Shri Raghunatha Temple MSS. Library, JAMMU

No. ५६४० घ

Title श्री शिवकवचम

Author

Extent १६ AGE. १९५४

Subject तन्त्रम संपूर्णम

© Dharmartha Trust J&K. Digitized by eGangotri

57

शिवकवच

नं० ११८०

© Dharmartha Trust J&K. Digitized by eGangotri

© Dharmartha Trust J&K. Digitized by eGangotri

१३२ नं. ~~२२३~~

नं० ५६४० - घ

१२६ श्री शिवकवचम (तन्त्रम)

~~पत्राणि १६ (षोडश)~~ ० (संपूर्णम)

११

5640

संवत १९५४

नं. ११२० क
शिवकवच
सं. ५४

श्री रघुवीर पुस्तकालय मंदिर ... नं. ११२० ... ५५

© Dharmartha Trust J&K. Digitized by eGangotri

शि॰ ॐनमःशिवाय ॐवज्रदंष्ट्रंत्रिनयनं काल
क॰ कंठमरिंदमं सहस्रकारमत्युग्रं वंदेशंभुमुमा
१ पतिं (अतःपरंसर्वपुराणगुह्यं निःशेषपापौ
घहरंपवित्रं जयप्रदंसर्वविपद्विमोचनं-
वक्ष्यामिशैवंकवचंहितायवै ॥ॐअस्यश्री
शिवपंचाक्षरमंत्रस्य वामदेवऋषिः पंक्ति
छंदः श्रीसदाशिवोदेवता ॐवीजं नमःशक्तिः

© Dharmartha Trust J&K. Digitized by eGangotri

शिवायेतिकीलकं श्रीशिवप्रसादसिद्ध्यर्थे-
पाठेविनियोगः ॐवामदेवऋषयेनमः शि
रसि पंक्तिच्छंदसेनमोमुखे सदाशिवोदेवता
यैनमः पादयोः शिवायेतिकीलकायनमः
सर्वांगे अथमंत्रन्यासः ॐसर्वंवीजात्मने
हृदयायनमः ॐनंनित्यधाम्नेशिरसेस्वाहा ॐ
मंश्रनादिशाक्तिधाम्नेशिखायैवौषट् ॐशिं-

© Dharmartha Trust J&K. Digitized by eGangotri

शि॰
क॰
२

2

स्वतंत्रशक्तिधाम्नेकवचायहुम् ॐवांअलुप्त
शक्तिधाम्नेनेत्रेभ्योवौषट् ॐयंअनंतशक्ति
धाम्नेअस्त्रायफट् ॐसर्वबीजात्मनेअंगु-
ष्ठाभ्यांनमः ॐनंनित्यधाम्नेतर्जनीभ्यांन
मः ॐमंअनादिशक्तिधाम्नेमध्यमाभ्यांनमः
ॐशिंस्वतंत्रशक्तिधाम्नेअनामिकाभ्यांनमः-
ॐवांअलुप्तशक्तिधाम्नेकनिष्ठिकाभ्यांनमःॐ

© Dharmartha Trust J&K. Digitized by eGangotri

यंअनंतशक्तियाम्नेकरतलकरपृष्ठाभ्यांनमः
अथध्यानम् ॐध्यायेन्नित्यंमहेशंरजतगि
रिनिभं चारुचंद्रावतंसं रत्नाकल्पोज्ज्वलां-
गंपरशुमृगवरा भीतिहस्तंप्रसन्नम् पद्मा
सीनंसमंतात्स्तुतममरगणै र्व्याघ्रकृत्तिंव-
सानम् विश्वाद्यंविश्ववंद्यंनिखिलभयहरंपं
चवक्त्रंत्रिनेत्रम् इतिध्यानम् ॐमानसो

© Dharmartha Trust J&K. Digitized by eGangotri

शि॰
क॰
२
३

पचारैः संपूज्य ॐ लं पृथिव्यात्मकं गंधं स
मर्पयामि नमः ॐ हं आकाशात्मकं पुष्पं ।
शिरसे स्वाहा यं वाय्वात्मकं दीपं शिखायै व
षट् रं पद्म्यात्मकं दीपं कवचाय हुम् वं अ
मृतात्मकं नानानैवेद्यं नेत्रत्रयाय वौषट् सं
सर्वात्मफलमूलतांबूलानि च अस्त्राय फट्
मूलमंत्रं दशधा जपेत् रुद्रगायत्रीं पठेत्-

© Dharmartha Trust J&K. Digitized by eGangotri

ॐश्रीऋषभउवाच ॐनमस्कृत्यमहादेवं
विश्वव्यापिनमीश्वरम् वक्ष्येशिवमयंवर्म
सर्वरक्षाकरंन्नृणां शुचौदेशेसमासीनो य
थावत्कल्पितासनः जितेंद्रियोजितप्राण
श्चिंतयेच्छिवमव्ययं हृत्पुंडरीकांतरसन्नि
विष्टं स्वतेजसाव्याप्तनभोवकाशं अतींद्रि
यंसूक्ष्ममनंतमाद्यं ध्यायेत्परानंदमयंम

© Dharmartha Trust J&K. Digitized by eGangotri

शि॰ हेशं ध्यानावधूताखिलकर्मबंध श्चिरंचि
क॰ दानंदनिमग्नचेताः षडक्षरन्याससमाहिता
४ त्मा शैवेनकुर्यात्कवचेनरक्षाम् मांपातु
५ देवोखिलदेवतात्मा संसारकूपेपतितंग
भीरे यन्नामदिव्यंवरमंत्रमूलं ध्वनोतुमे
सर्वमघंहृदिस्थम् सर्वत्रमांरक्षतुविश्व
मूर्तिर्ज्योतिर्मयानंदघनश्चिदात्मा अणो

© Dharmartha Trust J&K. Digitized by eGangotri

रणीयानुरुशान्तिरेकः सईश्वरःपातुभयाद
शेषात् योभूस्वरूपेणाविभर्तिविश्वंपायात्स
भूभोगिरिशोष्टमूर्तिः योपांस्वरूपेणान्टणां
करोति संजीवनंसोवतुमांजलेभ्यः कल्पा
वसानेभुवनानिदग्ध्वा सर्वाणियोन्टत्यति
भूरिलीलः सकालरुद्रोवतुमांदवाग्ने र्वात्या
दिभीतेरखिलाच्चतापात् प्रदीप्तविद्युत्कन

© Dharmartha Trust J&K. Digitized by eGangotri

शि॰ क॰ ५
5

कावसामो विद्यावराभीतिकुठारपाणिः

चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यांदिशिर

क्षतुमामजस्रम् कुठारवज्रांकुशपाश

शूलकपालढक्काक्षगुणान्दधानः चतु-

र्मुखोनीलरुचिस्त्रिनेत्रः पायादघोरोद

शिदक्षिणस्याम् कुंदेंदुशंखस्फटिकावभा

तो वेदाक्षमालावलयाभयांकः त्र्यक्ष

द्वि शर्मा

© Dharmartha Trust J&K. Digitized by eGangotri

श्चतुर्वक्त्रउरुप्रभावास्सद्योधिजातोवतु-
मांप्रतीच्याम् वराक्षमालाभयढक्कहस्तः
सरोजकिंजल्कसमानवर्णः त्रिलोचन
श्चारुचतुर्मुखोमां पायादुदीच्यांदिशिवा
मदेवः वेदाभयेष्टांकुशपाशशाङ्गं कपा
लढक्काक्षत्रिशूलपाणिः सितद्युतिः पंचमु
खोवतात्मा मीशानमूर्ध्वंपरमप्रकाशः-

© Dharmartha Trust J&K. Digitized by eGangotri

शि॰ क॰ ६

मूर्धानमव्यात्मम चंद्रमौलि र्भालंममाव्या

दथभालनेत्रः नेत्रेममाव्याद्भगनेत्रहारी ना

नांसदारक्षतुविश्वनाथः पायाच्छ्रुतिंमेश्रुति

गीतिकीर्तिः कपोलमव्यात्सततंकपाली

वक्त्रंसदारक्षतुपंचवक्त्रो जिह्वांसदारक्षतु

वेदजिह्वः कंठंगिरीशोवतुनीलकंठः (स्कं

दौवृषस्कंधगतःसदाव्यात् स्तनद्वयंपातुस

6

१॰ केतु

© Dharmartha Trust J&K. Digitized by eGangotri

दामहेशः पार्श्वद्वयंमेभगवानिरीशः भुज
द्वयंपातुभुजंगधारी)पाणिद्वयंपातुपिना-
कपाणिः दोर्मूलमव्यान्ममधर्मबाहुर्वक्ष
स्थलंदक्षमखांतकोव्यात् ममोदरंपातुगि
रींद्रधन्वा मध्यंममाव्यान्मदनांतकारी
हेरंभतातोममपातुनाभिं पायात्कटिंधूर्ज
टिरीश्वरोमे (गुह्यंहरोरक्षतुवास्त्वकेशः प

© Dharmartha Trust J&K. Digitized by eGangotri

शि॰ ष्टंममाव्याद्गगनाम्बईशः) ऊरूद्वयंपातुकु
क॰ वेरमित्रो जानुद्वयंमेजगदीश्वरोव्यात् जं
७ घाद्वयंपुंगवकेतुरव्या त्पादौममाव्यात्सुर
वंद्यपादः महेश्वरःपातुदिनादियामे मांम
ध्ययामेवतुवामदेवः त्र्यंबकःपातुतृ
तीययामे वृषध्वजःपातुदिनांतयामे पा
यान्निशादौशशिशेखरोमां गंगाधरोरक्षतु

© Dharmartha Trust J&K. Digitized by eGangotri

मांनिशीथे गौरीपतिःपातुनिशावसाने मृ
त्युंजयोरक्षतुमांप्रभाते गृहास्थितंरक्षतुशं
करोमां स्थाणुःसदापातुवहिःस्थितंमां त
दंतरेपातुपतिःपशूनां सदाशिवोरक्षतुमांस
मंतात् तिष्ठंतमव्याद्भुवनैकनाथः पाया
द्व्रजंतंप्रमथाधिनाथः वेदांतवेद्योवतुमां
निषण्णं मामव्ययःपातुशिवःशयानं मा

© Dharmartha Trust J&K. Digitized by eGangotri

शि॰
क॰
८

र्गेषु मां रक्षतु नीलकंठः शैलादिदुर्गेषु पुर
त्रयारिः अरण्यवासादि महाप्रवासे पाया
न्मृगव्याधउदारशक्तिः कल्पांतकालोग्रप
टुप्रकोप स्फुटाट्टहासोच्चलितांडकोशः घो
रारिसेनार्णवदुर्निवार महाभयाद्रक्षतु वीर
भद्रः पत्यश्वमातंगघटावरूथिनां सहस्र
लक्षायुतकोटिभीषणां अक्षौहिणीनां शत

© Dharmartha Trust J&K. Digitized by eGangotri

माततायिनां भिंद्यान्मृडोघोरकुठारधारया
निहंतुदस्यून्प्रलयानलार्चि र्ज्वलत्त्रिशूलंत्रिपु
रांतकस्य शार्दूलसिंहर्क्षवृकादिसंघा न्संत्रा [हिंस्रान्]
[विश्वधन:] सयत्वीषधनुःपिनाकः दुःस्वप्नदुःशकुनदु
र्गतिदुर्मनस्य दुर्भिक्षदुर्व्यसनदुःसहदुर्यशां
सि उत्पाततापविषभीतिमसद्ग्रहार्तीन्व्याधीं
श्चनाशयतुमेजगतामधीशः अथसहस्रा

© Dharmartha Trust J&K. Digitized by eGangotri

शि॰ क॰ ९

१

ततोमंत्रः ॐनमोभगवतेसदाशिवाय
सकलतत्वात्मकाय सर्वमंत्रस्वरूपाय
सर्वयंत्राधिष्ठिताय सर्वतंत्रस्वरूपाय
सर्वतंत्रविदुराय ब्रह्मरुद्रावतारिणे नी
लकंठाय पार्वतीमनोहरप्रियाय सोम
सूर्याग्निलोचनाय भस्मोद्धूलितविग्रहा
य महामणिमुकुटधारणाय माणिक्यभू

© Dharmartha Trust J&K. Digitized by eGangotri

षणाय सृष्टिस्थितिलयकारणाय दत्ता
ध्वरध्वंसकाय महाकालभेदनाय मूलाधा
रैकनिलयाय तत्वातीताय गंगाधराय
सर्वदेवादिदेवाय षडाश्रयाय वेदांतसा
राय त्रिवर्गसाधनाय अनेककोटिब्रह्मां
डजनकाय अनंतवासुकितक्षककर्कोटक
शंखकुलिकपद्ममहापद्मेत्यष्टमहानागकु

© Dharmartha Trust J&K. Digitized by eGangotri

शि· लभूषणाय प्रणवस्वरूपाय चिदाकाशा
क· या काशादिस्वरूपाय सकलग्रहनक्ष
९ त्रमालिने सकलाय सकलकलंकरहि
10 ताय सकललोकैककर्त्रे सकललो
कैकहर्त्रे सकललोकैकभर्त्रे सकललो
कैकगुरवे सकललोकैकसाक्षिणे स
कलनिगमगुह्याय सकलवेदांतपार-

© Dharmartha Trust J&K. Digitized by eGangotri

गाय सकललोकैकवरप्रदाय सकलदु-
रितार्तिभंजनाय सकलजगदभयंकरा
य सकललोकैकशंकराय शशांकशे
खराय शाश्वतनिजावासाय निराभासा
य निरामयाय निर्मलाय निर्लोभाय नि
र्मदाय निश्चिंताय निर्हंकाराय निराकुला
य निष्कलंकाय निर्गुणाय निष्कामाय-

© Dharmartha Trust J&K. Digitized by eGangotri

शि· निरुपप्लवाय निरवंध्याय निरंतराय नि
क· ष्कारणाय निरातंकाय निष्प्रपंचाय निः
११ संगाय निर्द्वंद्वाय निराधाराय नीरागाय
।। निष्क्रोधाय निर्मयाय निष्पापायनिर्भ-
याय निर्विकल्पाय निर्भेदाय निष्क्रिया
य निरंजनाय निष्क्रियाय निःसंशयाय
निरूपमविभवाय नित्यशुद्धबुद्धपरिपू-

© Dharmartha Trust J&K. Digitized by eGangotri

ॐ सच्चिदानंदाद्वयाय परमशांतरूपाय
जय २ रौद्र महारौद्र वीरभद्र भद्रावतारस्वे
च्छावतार महाभैरव कालभैरव कपा
लमालाधर खट्वांग खड्ग चर्म पाशांकुश
डमरु त्रिशूल चाप बाण गदा शक्ति:
भिंडिपाल तोमर मुसल मुद्गर पाश परशु
परिघ भुशुण्डि शतघ्नि चक्रायुध भीष

© Dharmartha Trust J&K. Digitized by eGangotri

शि॰ णाकार सहस्रमुख दंष्ट्राकरालवदन वि

क॰ कटाट्टहास विस्फारितब्रह्मांडमंडल-

१२ नागेंद्रकुंडल नागेंद्रहार नागेंद्रवलय व्या

12 घ्रचर्मवेष्टित नागेंद्रचर्मांबरधर मृत्युं

जय त्र्यंबक त्रिपुरांतक नागेंद्रचर्मांब

रधर वृषभवाहनाविश्वभूषण विश्वतो

मुख सर्वतोमुख ज्वल २ महात्रिकाल

© Dharmartha Trust J&K. Digitized by eGangotri

कंठचोरऽप्रपमृत्युभयंनाशय २ चोरभय
मुत्सादय २ विषसर्पभयंशमय २ चोरभ
यंनाशय २ चौरान्मारय २ शूलेनाविदारय २
शत्रूनुच्चाटय २ कुठारेणभिंदि २ खड्गेन
छिंदि २ खट्वांगेनविपोथय २ मुसलेन-
निष्पीषय २ बाणैःसंताडय २ तृतीयनेत्रे
णसंतापय २ रक्षांसिभीषय २ अशेषभू

© Dharmartha Trust J&K. Digitized by eGangotri

शि॰ तानिविद्रावय २ कूष्मांडवेतालमहामा
क॰ रीगणब्रह्मराक्षसान्संत्रासय २ ममाभयं
ख॰ कुरु २ वित्रस्तमाश्वासय २ न्दुजडाभ्यां
13 मामाप्याय २ दुःखातंमामानन्दय २
नरकभयान्मामुद्धर २ शिवकवचेनमा
माच्छादय २ मृत्युंजय त्र्यम्बकसदाशि
१०१ वनमस्ते २ श्रीभीष्मउवाच इत्येतत्क

© Dharmartha Trust J&K. Digitized by eGangotri

वचं शैवं परमं व्याहृतं मया सर्बवाधा
प्रशामनं रहस्यं सर्वदेहिनाम् यः सदाधा
रयेन्मर्त्यः शैवंकवचमुत्तमम् नतस्य
जायतेक्वापि भयं शंभोरनुग्रहात् क्षी
णायुः प्राप्तमृत्युर्वा महारोगहतोपिवा
सद्यः सुखमवाप्नोति दीर्घमायुश्चविंदति
सर्वदारिद्र्यशमनं सर्वमंगल्यवर्धनम्

© Dharmartha Trust J&K. Digitized by eGangotri

शि·
क·
१४
14

योधत्तेकवचंशैवं सदेवैरपिपूज्यते महा
पातकसंघातैर्मुच्यतेचोपपातकैः दे
हांतेमुक्तिमाप्नोति शिववर्मानुभावतः
त्वमपिश्रद्धयावत्स शैवंकवचमुत्त
मं धारयस्वमयादत्तं सद्यःश्रेयोह्य
वाप्स्यसि सूतउवाच इत्युक्त्वावृषभो
योगी तस्मैपार्थिवसूनवे ददौशंखं-

© Dharmartha Trust J&K. Digitized by eGangotri

महानादं खड्गं चारिनिसूदनं पुनश्चमसा

संमंत्र्य तदंगे परितोऽस्पृशेत् गजानांष

ट्सहस्रस्य द्विगुणस्य बलं ददौ मत्प्र-

सादात्संप्राप्य क्लैश्वर्यं धृतिस्मृतिः स

राजपुत्रः शुशुभे शारदर्क इवाश्रिया तमा

हप्रांजलिभूयः सयोगी नृपनंदन एव-

खड्गो मया दत्तः सपो मंत्रानुभावतः शतधा

© Dharmartha Trust J&K. Digitized by eGangotri

शि· रमिमंखड्गं यस्मैदर्शीयसेस्फुटम् ससद्यो
क· म्रियतेशत्रु स्साक्षान्मृत्युरपिस्वयम् अ
१५ स्यशंखस्यनिर्ह्रादं येशृण्वंतितवाहिताः
15 तेमूर्छिताःपतिष्यंति न्यस्तशस्त्राविचेत
नाः खड्गशंखाविमौदिव्यौ परसैन्यविना
शनौ आत्मसैन्यस्यपक्षाणां शौर्यतेजो
विवर्धनं एतयोश्चप्रभावेन कँ शैवेनकव

© Dharmartha Trust J&K. Digitized by eGangotri

चेनच भस्मधारणसामर्थ्या च्छत्रुसैन्यंवि-
जेष्यासि प्राप्यसिंहासनंदिव्यं भोक्ष्यासिपृथि
वीमिमां इतिभद्रायुषंसम्यगनुशास्यतिमा
त्तकम् ताभ्यांसंपूजितःसोथ ययौस्वैरग
तिर्मुनिः इतिश्रीस्कंदपुराणे ब्रह्मोत्तरखंडे
ऋषभयोगीश्वरसंवादे शिवकवचंनाम
द्वादशोध्यायः १२ ॥ सं. १९५८ भाद्रे जन्मपक्षे =

© Dharmartha Trust J&K. Digitized by eGangotri

नं. ~~२२२~~

ग्रि·
का·
६
16

© Dharmartha Trust J&K. Digitized by eGangotri